६०७९

Shri Raghunatha Temple MSS. Library,
JAMMU

No. २६३५ / क

Title नारदगीता

Author

Extent १३ पत्र Age

Subject धर्मशास्त्र

(c) Dharmarth Trust. Digitized By eGangotri

नारदगीता नं. १७३५

6071.

F - 13

Complete

(c) Dharmarth Trust. Digitized By eGangotri

ॐ श्रीगणेशाय नमः ॥ नारद उवाच

ॐ भक्तानां च वनं श्रेष्ठं ज्ञानं के
न च लभ्यते ॥ एवं ज्ञातेन नूनं ना
र्तिश्च न जन्म न विद्यते ॥१॥
श्रीभगवानुवाच ॥ शरीरं सर्व

(c) Dharmarth Trust. Digitized By eGangotri

ना
१

विघ्नानं प्रीतिं सर्वदेवतानां ॥
प्रीतीं सर्वतोध्यानां गुरुहस्त
केषु लभ्यते ॥२ यावद्गुरुहस्त
कर्तव्यं विनायानं नाभिष्य
ति ॥ तस्माद्गुरुहस्तकर्तव्यं विना

(c) Dharmarth Trust. Digitized By eGangotri

गुरुनसिद्धिति ॥३॥ यथादीप
विनायेहनष्यातेगृहमेवच
श्रवणपगुरुकर्तव्यंस्वहृदि
लभेतेनर: ॥४॥ चंद्रहीनेय
थारात्रौसूर्यहीनेयथादिनं ॥

(c) Dharmarth Trust. Digitized By eGangotri

ना० न्यद्दीनैयथासैस्मात्गुह्यद्दी
१ नैयथानरः॥५॥नारदउवाच
2 जोगीजंगमसंन्यासीनव
साब्राह्मणास्तथा॥दीनायां
॥ गुह्यमाचकथंचगृह्यतो

(c) Dharmarth Trust. Digitized By eGangotri

मम॥८॥श्रीभगवानुवाच॥जोगी
जंनामसंन्यासीनचस्यश्रात्मए
त्तथा।सर्वंसर्वंसममगवासंती
तागरुवेवैसमता॥७॥दशक
मिश्रतावंधंविगाहंश्चाइतो

(c) Dharmarth Trust. Digitized By eGangotri

ना ३ येकं ॥ घटस्यानेत्रगुर्विस्माद्री·

त्रागृहचवेस्मवा ॥ ७ ॥ पाषाणा

क्रियतेनैकास्मारभारनुषा

रयेत् ॥ रुद्रीगृहनकर्तव्या·

ननरंतिनकारयेत् ॥ ८ ॥ वेस्म

3

(c) Dharmarth Trust. Digitized By eGangotri

वाविनामंत्रंचरीनाशिक्षावि
नानरः॥ उभयोनरकंयातित्र
हशिक्षारसातले॥ १०॥ कादृम
क्रियतेनाकगृहक्रियांतवै
स्रवा॥ तेमृकिंचकालेनमम

(c) Dharmarth Trust. Digitized By eGangotri

ना॰ वर्णांस्तगच्छति ॥ ४ ॥ नपंकेव
५ च्यते पंके क्रियते कोटिपा
क्रमे ॥ निर्मलजलैर्वल्मवाको
टिपापैप्रमुच्यते ॥ ५ ॥ व्याकुलि
विनावाणीं च ॐजनं लवणि

(c) Dharmarth Trust. Digitized By eGangotri

विना। वैस्नवाविनादीनांचम
नंस्तस्यचनारद ॥ ४ ॥ निंदंतेवे
दशास्त्राणि वैस्नवा ब्राह्मणा
निंदंते ॥ बाह्यकर्मरहस्याणि
विष्णाय्यांजायतेवामि ॥ ५ ॥ वैस्न

(c) Dharmarth Trust. Digitized By eGangotri

गी
५

वाश्रेष्ठमध्ये ह्यं संसारखलना
सितो ॥ निंदकोनरकेयाति
ख्यातसुकरसंगुन ॥ ५ ॥ वैस
वाममदेहैवसमस्तसर्वंचना
रद ॥ विचारणसुतोयनज्ञा

5

(c) Dharmarth Trust. Digitized By eGangotri

रजातकमनत्यतै ॥ ५ ॥ ८ ॥ गृह्वा
काक्रियतेशिष्यंगृह्मंकि
रतेसदा ॥ अग्राज्ञावंशनकर्त
वेनरोमृक्रिंनृसंप्राय ॥ ७ ॥
गृह्वाकंसनकर्तेभ्यंगृह्णा

(c) Dharmarth Trust. Digitized By eGangotri

ना
५

गयानमस्मै॥ नैमिष्यं नरके
यांति यावच्चंद्रदिवाकरः॥८
वेदशास्त्रपुराणास्य दानको
6 टिचतीर्थके॥ गुरुणीनावि
हीनस्यातिष्फलंनसासर्वशः॥९

शिवाह्यीतं क्रियते प्रज्ञातस्य

प्रज्ञातिरर्थकं ॥ च रागास्तंस

रापावेत्तुलसीदलकंपंच ॥ २ ॥

प्रज्ञाविनायथ्याभार्यादेववि

नादेवस्यले ॥ विनादेवविना

(c) Dharmarth Trust. Digitized By eGangotri

गी
७

भक्तिविनाभक्तिनलभ्यते॥ ५१
वेइालदर्शनेवेवस्त्रइद्वयवि
दर्शनं॥ ग्रदीविनादर्शद्वीनं
स्यनवस्त्रइस्त्रवृणांविना॥ ५२॥
यावत्कुलसग्रदोलमा॥ पिनः

(c) Dharmarth Trust. Digitized By eGangotri

योऽनलभयते ॥ अयोगातिनर
केयांतिभ्रमतिगोत्रजल्पया ॥ १३
नस्मापित्रकृद्वंतंकृतांकोपग
मासन्नभत्यते ॥ यादिग्रहचा-
कतेवंपंचपकोनवंशाते ॥ १४

(c) Dharmarth Trust. Digitized By eGangotri

गी
८

8

ग्रहमंत्रप्राप्यतेयदानरामुक्ति
लभन्तेनर।दीक्षायांगामस्क्र
नापिपितृहर्षितिनादिना॥२५
नारदउवाच॥प्रकृतींक्रियते
ह्लादंइंद्रियाभक्तिमेवच॥म

(c) Dharmarth Trust. Digitized By eGangotri

नस्प्रांतिनिकर्माणीतियस्यन
किंचमेवच ॥१९॥ श्रीभगवान्
वाच ॥ ममममानंगाङ्गेयेणज्ञात
ग्रंकृशमेव ॥ त्वब्राह्मणाशील
वंतश्च सर्वपापैःप्रमुच्यते ॥ २

(c) Dharmarth Trust. Digitized By eGangotri

गी
५
१

पक्वत्वं पंचत्वाद्देभिन्नाभिन्न
चमेव च ॥ पंचत्वादन्नजाता·
भिस्मायवोभवतन्त्रयं ॥ २ ॥ स
म्पूर्णो द्वादशवर्षाणि त्रेता
यां सममेव च ॥ द्वापरे पंचव·

(c) Dharmarth Trust. Digitized By eGangotri

गति कलियुगे भक्तिमेव च । १९
सत्ययुगे लिवलोतं च त्रेतायां
ध्यानमेव च ॥ द्वापरे होमयत्त
श्च कलियुगे भक्तिमेव च ॥ ३ ॥
पुनः चितं पुनः चितं क्रियते

(c) Dharmarth Trust. Digitized By eGangotri

गी
१०

कर्मिश्च भास्त्रमं। आत्मा वै सम:
कृत्वा च तत्रैव लव: पं पदं॥ ३१
मत्व पवित्रं सहस्र नामं हल
पवित्रं पात्र दानं॥ शरीर पवि
त्रं गंगा स्नानं पिंड पवित्रं ब्रल

(c) Dharmarth Trust. Digitized By eGangotri

गीतं ॥ २५ ॥ गंगागीतावैवैखवा
कपिलायेनमेवच ॥ हरिनाम
यथापंसंवैखवानौकाकलि
युगे ॥ २६ ॥ ततवैनावयश्रेष्टति
कलंकिंनिलोभिता ॥ बहुणा

(c) Dharmarth Trust. Digitized By eGangotri

गी ह्यविनावैष्णवाभक्तिचगुरुना
११ रद॥३५॥श्रीविष्णुस्तिस्मश्रीलक्ष्
मासमचासमहाहरं॥गुरुभक्ति
गवेहीनेकर्तव्यंशिवनारद॥३६
ननवेनाविनानारदहरीत्नावि

नैसर्गोच्छिष्टं ध्यानमाञ्जौ रक्तक
टाः॥ स्वकैरातिं दकश्चैव नचावे
श्रामात्तनयाः॥ यदा॥ वाक्यं स्कतोय
मस्नाय हृत तहृषींघ्नपापागतः॥ हृत
हृषीघ्नपापागताः स्वयं विचार्य हेडताः॥ ५२

(c) Dharmarth Trust. Digitized By eGangotri

गी
१२ 12

इदंस्तोत्रंमहापुण्यंत्रपमरस्त्रावि
नाशनं॥ संध्याकालेपठेन्नित्यं
धर्मेवाकमकनमे॥१०॥अपुत्रो
लभतेपुत्रंनिर्धनोलभतेधनं॥
मार्यार्थिनोमुच्यतेरोगान्विमुंचे

(c) Dharmarth Trust. Digitized By eGangotri

नाचयोनरः॥ उभयोनरकेयां·
तिगृहतिश्चरसानले॥२६॥वे
दशाहेवमात्मानंनमावेति·
ष्ठयमानरः॥अज्ञानेचममद्रो
हीनरकेयांतिपुनःपुनः॥२७॥

(c) Dharmarth Trust. Digitized By eGangotri

६१

ना॰ इतिश्रीकल्पनारदसंवादेनारदगी

१३ नामसहस्त्रम

13

७३८

१८३१

(c) Dharmarth Trust. Digitized By eGangotri